M. T. B. COLLEGE, SURAT
Manuscripts Library
No. Ref.
Ser. 1273
Title: Chokha Raja Shloka

1273

Incomplete

C

	Chakra Raja Stotra		Title
			Author
			Editor
Sk			Year, Vols.
			Publisher
1273		Pages 85 to 105	Remarks

मृदेवेनआनंदत्तात्ताद्विस्तृतद्धुःरेवेनद्विति द्विताराव: कृत:॥८१॥ पदंतेभ्रांती
नांअपदस्यपदंदे विविपदाभ्यथंनीनिंअङ्गि: कठिनअमठीअपरिस्तुत्तौ। अयंचाहस्तात्या।
कुपनयनआप्तेपुरत्निहात दादायन्यस्तंदृष दिदयमानिनमनआ॥८७॥ ईपुरमे
श्चरिआइक्तत्ताति नेओल्लाग्यमुदरं तवचरणंपदस्छानंभ्रांतीनांमनुपमामितिप्र
सिद्धमेवतत्रापि उपमादीयत एवेई तिमइस्तुचितं। ततोपितस्यचरणारविंदस्यप्र
पदंअठिनिनअभ्रीनअमठीअण्परेणानुस्तयंति। नापेवंतेषामनुचितत्वमारिणं। अ
नएवअनठीरवपरिस्तुत्तांअमयाः अछपवद्धः पपरिरवीणाद्दृशेलागेनतुषोतप
मानेअथंनीतंअङ्गि: अंतएवतेनत्तवंतीया क्षेपः इदेवितवरवत्तुअमदस्यअतु
त्तस्यापितुप्ताअंपादनं॥ विपदेचविपदामपदेतचअपदेतचअपूदेविपदुत्प
त्तिरनुचितेतित्नाचः॥ अतएवोक्तंविपदामपदमित्येवंअपदस्यऔत्त्यायंचण
पिचातदेवचिशिनष्टिपूर्वंविवाहआप्तेउपनयनआप्तेपुरत्तिदामरादेवेनदृ
षदिविवाहअनौचितेमस्तरे। आरोहेममरमुखानमरमेचत्वंस्थिरानचेतिमं
त्रेणवारणाअन्यायाः चरणमरमानि निधीयेचेदिङेभ्यस्वातंत्र्यदेनएवदयमा।

नेनदयां कुर्वता मनसा मत्पुरत्ति हा महादेवेन पाणिभ्यां उत्ताल्यामपि गृही
त्वा दृषदि तन्नू चरणं कथं न्यस्तं। अति दुःखेनैव भगवता कर्मसंवत्सौ रिलिष्टं
अलक्ष्या शनैः शनैरेव प्रसूता विन्यस्तं दुःखेन यत्नेन कृतमिति कथं। अस्यापि
विवाहवेलायां प्रथमतएवं सर्वाचारोपदेशकेन महादेवेन यत्तु त्वच्चरणग्र
हणं क्रियते न तत् प्रार्थनान्तर्थे वेदपरमेश्वरिकार्लाउ गृहे अहं गृही त्वं गृहिणीय ३
मानिरारोन निश्चितेन परकल्पानुसंधानं क्रियते। यद्येवं गृहिण्यास्त्वं तोष
पोषणीयाः ममापि कार्यं च यदेव कर्तव्यं। तो भे गृहकारणं गृहिण्या गृहिण्या
य क्रियते गृहिण्या वदुर्ध्य नगृहिण्या गृहे रक्ते नत्वज्यते सर्वपुत्रमित्रादि
भिः। मम तु गृहकारणं तो मानुगामी। अहं भवतो मध्यस्थः यदि विन्यस्त लाल ८५
चन्नी तानायदरी। यद्येवमचेष्टामपि कर्तव्या सर्वोपि गृहसंसारनिर्वाहः क
र्तव्य इति चरणग्रहणस्य चाभ्ना न तन्त्री कृष अन्येषामपि मनुष्यादीनां विवा
हसमय असम निकन्या वरण पणयाजातं गृहिणीवेव गृहिणो धर्मार्थकाममो
क्षयत्तविधिपुरुषार्थस्यापि भाजनत्वं तं खलु पातिव्रत्यं तोऽसि प्रसिद्धं तेन

च मम ब्राह्मणविहितकर्म यशान्तपस्याश्रमाय परस्परं सर्वनिर्वाहस्त्वयैव कर्तव्य
इति खलु चरणवंदनं क्रियाते। वंदनं खलु गृहरणमेव स्त्रीणां शुक्रपैः चरणग्र
हणं कथमिति चेत्तत्रैव स्मृतिवचनं धर्मशास्त्रादीपिकास्तु धर्मांगे अपि स्त्रियो
मेध्य एव पवित्रा एव। अत एव तीर्थस्तुता स्त्रियः। अस्त्र स्कम्बु खतो मेध्य गा
वो मेध्य तु पृष्ठतः। ब्राह्मणाः पादतो मेध्यः स्त्रियो मेध्यास्तु सर्वतः। इति स्मृ
ति वचनात् प्रामाण्यात् सर्वांगेषु धरं कुमना दोषः ननु स्त्री मुखं तु अधाम्र
यीति वचनात् अधरं कुमन मात्रमेवाचारोभवतु इतरकुंमनेषु प्रामाण्याभा
व इति चेत् न स्त्रियो मेध्यास्तु सर्वत इति मेध्यतावचन सत्तेन सर्वांगे पवित्रा
णां स्त्रीणां नयनदोषात् कुचायवनाभि मूलस्परणाय चुमनानि कामशास्त्र
निधानि महाकविभिरपि काव्येषु प्रयुक्तानि। प्रामाणिकाश्चेतानि स्त्रीणां स
र्वांग पवित्रतां विना न संभवति॥ इत्थं पवित्राणां स्त्रीणां विवाहसमये चर
णग्रहणं न दोषः नाः खलु स्त्रीयो महतीलि र्दैवतालिः कृता कुमहानियप

चित्रा एव जायंते। तां खलु कन्यां विवाहादिवसादिनेषु प्रथमरात्रौ सोमो भुन
योक्त्वा भुक्त्वा गच्छन् वरं ददाति। किं तं नियमस्तु अतो स्तनेष्वस्तानेपि स्त्रियः स
र्वदा पवित्रा एव सोमः शौचं ददौ तासामिति वचनात्। द्वितीयरात्रौ तां कन्यां गं
धर्वराजो भुक्त्वा सोमः प्रथमो विविदे गंधर्वो विविदे उत्तर इति वचनात्। अष्टवि
र्षा वस्तु गंधर्वराजः तां कन्यां भुक्त्वा गच्छन् वरं ददाति। गंधर्वश्च शुभां गिरमिति
वचनात् वाचः सौलण्यं ददाति स्त्रियः खलु तोमे चयोपि स्खलंतं स्वनालवंति।
स्खलन्त्यस्तपंच्यः। स्खलच्चगायंत्यः। तृतीयरात्रौ भगवान् यज्ञपुरुषो वह्निः तां
कन्यां भुक्त्वा गच्छन् वरं ददाति सर्वलक्ष्यालवेदिति। अतः स्त्रीणां सर्वलक्षणे दो
षो नास्ति लक्ष्यालक्षविचारस्त्वन्योस्तथापि पवित्रा एवं। वरं प्रदायकं तो गो
पि। वेदेन अग्निस्तृतीयो अग्निष्टे पतिरिति। एवमेव महतां देवतानां अनु
ग्रहेमत्रिग्रहीणी। जनस्य ग्रहीजनेन क्रियमाणेन ग्रहणार्हविवेदने दोषं ८५
अस्मंतं सोपि दुरापरास्तः ॥८७॥ नरवैना अस्त्रीणो अस्क्रमतस्मं सोयशाभिन्नित्य

स्तुणो दियानां हस्तिर्त्विते चंडिचरणौ। प्रशानि स्वस्थे चिन्त्यः त्रिशापत्यक्रराग्रेण
२६ दधती हरिद्रेन्त्योलग्नां श्रियमनिशमक्वायदधतो ॥८८॥ इ चंडिमहायोगिनो
योगश्लिष्ये नन्नृह्यदयमंजातयोगनिम्नन्तु तस्कामक्रोधलत्यमदमास्सर्यादि
रिपवर्गस्तिपमहेशैरक्तमहिषासुररक्तबीजशुंभनिशुंभप्रभृतिदैत्यमत्तदर्पम
टनायचंडनतया क्रोधनतया ग्रहीतदुग्रविषायं चंडिचेमे वर्तिविंशतिमो क्तयं
नीतिनत्वात्मा मस्तुधिसोधितेतव प्रयामेस्वस्थेन्त्यः स्वर्गवासिन्त्यः हरणे
दुनेन्त्यश्च त्रिशापत्यअस्त्राग्रेण प्रह्लवहस्तेन प्रशानि दधती अत्पनकणीनश्वर
णोहमंतर्ईवतेन प्रस्नोरेणुणाधिक्या क्षितद्गुणाधिक्षि नाम हे खलु भक्तानवः
स्वयं दर्स्वेन्त्यः ह्रणघिन्त्यः धनं प्रयच्छंति न वचरणौ हरिद्रेन्त्यः अश्लिप्य नेन्त्यः लग्नां
अस्ताणीं श्रियं धनस्थंपदमनिशं अनवरदेवमश्चायवेगेन अकरियं तत्रात्रायम
द्यस्त्रागनं यत्वयक्तता इति दधतौ अवदि हात्वम्य कौशात्रं तस्य वर्तमानप्राप्त
संबंधनु तवचरणयोर्हनि अस्र्म चिरहो नास्ति एवं भूतौ तव चरणौ ना अस्क्रीणो

देवांगनानां अक्षमत्वं क्षोभयितुं शक्तिः अक्षमत्वं क्षोभकर्मणि सक्तायमनो देव
स्त्रियः खलु क्षेवास्वानमस्कारवेलायां अक्षमत्वस्य अंक्षोभो भवति इदं दूरे निर्वि
देतप्रकारैरिव दिव्यानां देवनकुणां सत्ररिव देवनकूनु इत एवैयर्थः विचक्षा
सूकार कानिलवंती निवरकुचिवस्त्रन्यायान्। कर्माणि षष्ठीति चिचक्षितां॥
क्षाकालेमातनयययकसिनाप्तकस्त्रंपिमेयं चिद्याया॥ तवचरणे निर्णेजन
जलं। प्रक्षाल्या सकलनामपि च विनाकारणं तया ... धत्ते वाणी मु
खकमलतां मूलरसम्॥ ॥श्लो॥ इमानः त्रिभुवनजननिम्नकाप्तः कल्लविशि
ष्यति। यदा यस्मिन्काले कालिनाप्तक कं रसं कलितं प्रक्षालनवेलायां अंत्रांते
आप्तकस्मलौलाग्येयस्यतत्नुतयोः। तवचरणनिर्णेजनजलं तव चरणप्र ८७
क्षालनजलं निजकधवितिधतो निःस्वर्वस्य चक्षुर्वोरनाको विचयनादेशो निर्णेजनमि
निरूपं तज्जनितं यत् जलं तत् कदा विद्याया॥ अनुपिमेयं तव देव जलं चिरिनक्षि प्र
क्षाल्य सकलानां प्रक्षाल्या स्वभावत एव सकलानां वर्कुमरीकानां कचिता कारणेनया
मारस्वतरेकंक्तततयायत् प्रख्यातं जलं च वाणी सुखकमलतां कूलरसम्

तांवाण्याः सरस्वत्याः मुखकमलजनितशोभावर्णनागवल्लीदलरसमाहरेयं
गृह्णाति खलु एव कथ्यते कापि हि तस्याः कवीश्वराः तपस्यासंतोषितायाः भग
वत्याः सरस्वत्याः मुखतांबूलंलब्ध्वा महाकवयो जाता इति तदर्थमत्र अनेन
श्लोकेन क्रियते॥ ॥श्लो॥ पद्मासनात्मकां जपपरिचयमिव तद्धुमनसः स्फुरेतः रे वर्त्तंतः श
रणकलहंसा न जहति। स्वविक्षेपपरिक्रोशलगमनेन मे जिरलि न च्छाता हार्य
हारणे चरणयुगलं च कस्य रिनै॥ ॥श्लो॥ हे परमेश्वरि पद्मासनाक्रीडापरिचयं चर
णविन्यासलीलया अंत्रापत्यं धुमनस्वि। आसमंतात् तव धुमनो ये षांतेन
योक्ताः। आङ् पूर्वो त जियथ पिश्चायां वर्त्तते तथा एतत्र प्राष्ट्यो वेद्ति तथ
स्यनेकार्थचातुर्थादसनां। आपत्तधुमित्रितुमुनोमकारलोपो। लुपि दचस्य मंत्र
शे उंश्राममनस्रोरपि इति वचनात् मकारलोपः ते खल्लीलारसं यथा भवन्ति
तथा चरतः संचारं कुर्वाणाः चरणकलहंसाः स्वरणे स्वरे वर्तमानाः कलहंसाः श
रणं गृहहरक्षितो रियमरः। कलहंसाः राजहंसास्तु ते चंचुचरणैर्लोहितैः सिते
रियमरः॥ तव चरणं न जहति न परित्यजंति रहाछ्यागईतिधातो। तिरिम्कु

वचनेरूपं। जहातिजहीतः जहति स्त्रिमर्थं नजहाति। शिष्याय्या उक्तं विद्या
न्याभिनः अवन्तेनयागतिनीस्तांशिक्षार्थं नचवरणं इमाः अवंते। स्तुभलगमणि
मंजीररणितछापात्। स्तुभलगस्यमनोहरस्यमणिमंजीरस्य। रत्ननूपुरस्यरणि
तछलात्। रुमरुमशब्दछ्याजात्। स्तुविक्षेपेस्वस्वपचरणस्यविन्याओरिकाम
प्ताप्तवचनमात्रस्थाणंकुर्वाण्यं। अन्योप्युपाध्यायः स्वयं प्रथमतत्रस्यचेष्टि
तं चकार। शिष्याः पठंति। पुनः क्लिप्तंचरणं चारुचरित्रं। मनोहरं चंक्रमणंअनेल
ग्नचरित्रंतु। चरित्रेस्यात्। अंचारेव्रतकर्मणीतिविश्वः। एवं क्लृप्तं विश्वः। चरणेउक्त
स्थानीयं शिष्यन्धृताः। अत इमाः नजहतीत्यन्वयः। अत्रैव श्लोके मरालविना एत
स्तोत्रं चक्रशंकरेणेच आत्मा आगमशास्त्रप्रसिद्धस्य नामस्यशारणस्य देवीस्तवनस्यास्य
चक्रराजस्यधन्यास्थानेवर्तमाना। अत इमाः चक्रादिदेवा चक्रादिदेयश्च प्रोच्यंते। ११
अत इमं वंचने प्रोच्यते। अत। अथ चक्रं धुरं वर्तमानोहंअः रतिमंत्रो येषां ते
अत इमाः सर्वेकाः चक्रादिदेवता स्तवपरा रात् तेदलितातलवंति। प्रथमं उक्तः
चक्रेश्वरः अनंतरं गणपतिः सर्वद्वारनिविष्टः। अष्टौ चरशानधातृणां उक्तं चक्र।

वतिस्तोत्रे। अत्रतस्त्री पुरगोपुराचिंतामणिगृहमुषधिपार्श्वे अष्टोत्तरशतधाति
नमरुणे। प्रणमो महागणनमितिं। नानावृक्षमहोद्याने भवतानाथः। ततः पूर्वस्मि
न्नायकात्वकुद्धरिपाप्तसेनाथः। कल्पतरुवाटिकायां निवसंतः। संतानवाटिका
यां ग्रीष्मनाथः। हरिचंदनवाटिकायां वर्षनाथः। मंदारवाटिकायां शरद्रुतुनाथः।
पारिजातवाटिकायां हिमर्तुनाथः। कदंबवाटिकायां शिशिरर्तुनाथः। तत्रैवरश्यामोवा
पुष्परागवाटिकायां सूर्यजयनाथः। पद्मरागवाटिकायां अनंगदेवी। गोमेदकवा
टिकायां। श्रीमातंगऋषिणी। हीरकरत्नवाटिकायां विश्वावसुगंधर्वपतिः। वैदूर्य
वाटिकायां अनंतनाथः। हरिमणिवाटिकायां वेदमाता गायत्री। मुक्तामणिवाटि
कासुर्वर्णागे देवेन्द्रनाथः तस्याः प्राग्दिशि भगवान् विश्वानरः। तस्याः याम्यायांय
मनाथः। तस्याः प्रागुत्तरे चिधिवत् रुद्रः। देवतात्तवाटिकायां वाचस्पति विक्रमरत्न
वाटिकायां अनलनाथः। माणिक्यमंडपे श्रीमहाविष्णुः। सहस्रस्तंभमंडपेशंभुना
थः। अमृतवाटिकायां नगदेवी। आनंदवाटिकायां वारुणीदेवी। विमर्शवाटिका
यां कुरुकुल्लादेवी। बालातपच्छायायां मार्तंडभैरवः। चंद्रिकोद्गारच्छायायां

ओम॰ श्रृंगारपरिखायां मन्मथनाथः। महापद्माटव्यां मंत्रिणी। चिंतामणिगृहराज
प्राकारद्वारे दुर्गाम्बिका रक्षिका। तस्योत्तरद्वारे गणपतिः श्रीमद्भैरविका। चिंतामणिगृहाभ्यंत
रे कुमारकामेश्वरः। पंचब्रह्ममहामंचाधस्ताद्वाकाली निम्बा। चिंतामणिगृहराज
पश्चिमे महाशंभुनाथः। चिंतामणिगृहराजद्वारे अनंतेश्वरी। चिंतामणिगृहरा
जस्य पिंडपीठे श्रीदुर्वासा। चिंतामणिगृहपूर्वद्वारे ऽमरमणिधिष्ठितमंत्रयंत्रक्रम
योगी। तस्यैव दक्षिणे नागमणिधिष्ठितमंत्रयंत्रवादी। चक्रराजमहारथस्थे गेय
तानन्दकारिका। श्रीचक्रस्थाने श्रीकामेश्वरानन्दकारिका। ६ अंगं पंचाशच्चक्रनायिका
मृतकं शब्दवाच्या। तेषां तस्याः श्रीनगरे ... निशांती याद्यापर्यन्तम्
क्रीडापरिचयं। आप्तस्कंधं मनस्य विपदानि स्यानानि चन्द्रशालवनानि तेषां न्या
मः त्वधिक्रीडारकाविधानं परिचयः। संहारः विज्ञचयनं इति धातुः। संहारमि २८
चत्ति। न्यायम्यक्रीडापरिचयश्चन्यान्ये क्रीडापरिचयं सर्वोपि ... विनाप
ये भवन्नुत्भवति। एतत्वात्तुमनस्यः त्रात्तुमानस्यः एतत् उक्तं भवति। स्वेच्छयैव
पदानां तु वनानां त्वधिक्षिति संहारका मर्यां प्रष्ठा इति अत एव रवेस्तं च

२

तंतः। केचित्तद्भावो चञ्चरणाध्यानमस्मये अत्तमर्थ्यं चरंतः तत्त्वमोचाराः
तत्परणं नजहति। श्रीदशांतवचनं स्वविक्षेपे स्वस्य आत्मनः विक्षेपे विवि
धतया ज्ञितीक्ष्य निरस्मने अविद्यायाः स्वस्वरूपशक्तिद्वयं आवरणशक्ति वि
क्षेपशक्तिश्चोभ्या स्वस्वरूपमल्पलाक्ष्य नाना चैव विक्षिपतीति चेतंत
म्निषंतीति नः अतः स्वस्य विक्षेपशीलनस्यात्मा च विक्षेपश्च स्वविक्षेपः अ
विक्षेपो विमलः अलक्ष्यानेन तस्मिन् स्वविक्षेपे विषय इति विषयलक्षणी न
र्यन्तियर्थः सुलग्नमणिमंजीररणितच्छलात् सुलग्नानां मणिः सुलग्नमणिः
सुलग्नः श्रेष्ठः श्रीकामेश्वरलक्षणः। मंजीरानामीशो मंजीरः मनोमनमोज
नत इति मंजः कामः अएषामस्ती ति मंजीनः सम्मारिणः तानीरयति प्रेरयति
दूरीकरोतीति मंजीरः शुद्धज्ञानविधिः परमहंसो निः कतः सुलग्नमणि
श्चमंजीरश्च उभौ सुलग्नमणिमंजीरौ भक्तनिः कतक्षलणीयर्थः। तद्विष
यंस्य रणानं रणितं तच्छलात् त[…]जानुत्कल्प निः कृतानि अंगुयानीनीनप

त भ्याजान

रंअस्त्येचरिक्तरूपमाचक्षाणेनतच्चरणक्रमत्वेयाकथयतिमनोहरवृत्तंनंनव
चरणक्रमत्वंअन्यचरणशब्देनमयाप्रकाशविमर्षद्वयमुच्यते। तदेवचरणेअ
हानंदरूपंचरणगतिरूपत्वाच्चरणयोरितिधातुःक्रमतत्वंचविमर्शात्मकंज्ञेयंधर्मि
त्वात्तुतस्यजगद्रूपेणस्फुरणायःयस्यस्वरूपेएवविमर्शस्यक्रमतत्त्वस्यचिन्म
यत्वंज्ञेयौस्वत्वाचन्निधत्ते। एवंतवमहःप्रकाशविमर्षरूपंचरणद्वयमनापरिग
णितंतत्त्वातिरिक्तंतत्स्वरूपंअस्यप्रतिपादकंआगमनामधेयंअथर्ववेदस्य।
रंमहःदर्शनंप्रवर्त्तयितुमेवभगवतीस्वस्मिन्नंतर्निगूढपरागादिदेवतां। पर
मेश्वरपरमेश्वरीअंशासम्यक्कादिरूपमामितिवचनप्रामाण्यात्। परमेश्वर
परमेश्वरीनामआदिस्वस्वसमयसंप्रदायप्रसिद्ध्यर्थंआप्नुतेचता। स्वस्य ८०
तस्याःशिष्योमित्रेशःतस्यषष्ठीशःतच्छिष्यःउड्डीशःतस्यशिष्यश्चर्यानाथः
तस्यशिष्योलोपामुद्रातस्याःशिष्योगस्त्यःशरीरःएताःसमग्रकुरूपाङ्क॥
भगवतीदेवतायांदेवतोक्तेदीक्षाक्रियैःअगस्त्यशिष्यःक्षततापिनः

× अनंगांकुशे। अनंगमालिनि

अहंकाराकर्षिणि। शब्दाकर्षिणि। स्पर्शाकर्षिणि। रूपाकर्षिणि। रसाकर्षिणि। गंधा
कर्षिणि। चित्ताकर्षिणि। धैर्याकर्षिणि। स्मृत्याकर्षिणि। नामाकर्षिणि। बीजाक
र्षिणि। आत्माकर्षिणि। अमृताकर्षिणि। शरीराकर्षिणि। सर्वाशापरिपूरक च
क्रस्वामिनि। गुप्ततरयोगिनि। अनंगकुसुमे। अनंगमेखले। अनंगमदने। अनंगमद
नातुरे। अनंगरेखे। अनंगवेगिनि। सर्वसंक्षोभिणि। सर्वविद्राविणि। सर्वा
कर्षिणि। सर्वाह्लादिनि। सर्वसंमोहिनि। सर्वस्तंभिनि। सर्वजृंभिणि। सर्ववशं
करि। सर्वरंजिनि। सर्वोन्मादिनि। सर्वार्थसाधिनि। सर्वसंपत्तिपूरणि। सर्व
मंत्रमयि। सर्वद्वंद्वक्षयंकरि। सर्वसौभाग्यदायकचक्रस्वामिनि। संप्रदा
ययोगिनि। सर्वसिद्धिप्रदे। सर्वसंपत्प्रदे। सर्वप्रियंकरि। सर्वमंगलकारि
णि। सर्वकामप्रदे। सर्वदुःखविमोचनि। सर्वमृत्युप्रशमनि। सर्वविघ्ननिवा
रिणि। सर्वांगसुंदरि। सर्वसौभाग्यदायिनि। सर्वार्थसाधकचक्रस्वामिनि।
कुलोत्तीर्णयोगिनि। सर्वज्ञे। सर्वशक्ते। सर्वैश्वर्यप्रदायिनि। सर्वज्ञानमयि। सर्व

याधिविनाशिनी। सर्वाधारस्वरूपे। सर्वपापहरे। सर्वानंदमयि सर्वैश्वर
क्षास्वरूपे। सर्वेप्सितप्रदे सर्वरक्षाकर स्वामिनी। निगर्भयोगिनी। वशिनि
कामेश्वरि मोदिनि विमले। अरुणे जयिनी। सर्वेश्वरि सर्वसिध्दप्राप्ति नि सर्वरो
गहर चक्रस्वामिनि रहस्ययोगिनि। श्री महाल्ड्झारिनि पाशांकुशि नि महा
कामेश्वरि महावज्रेश्वरि महाभगमालिनि महाश्री सुंदरी सर्वसिद्धिप्रदचक्र
स्वामिनि। अतिरहस्ययोगिनि। श्री महाल्ड्झारिने सर्वानंदमयचक्र स्वा
मिनि परापररहस्या योगिनि त्रिपुरे त्रिपुरेशि श्री त्रिपुरसुंदरी त्रिपुरवासि
नि त्रिपुराश्रीः त्रिपुरमालिनि। त्रिपुरसिद्धि त्रिपुरांबा महात्रिपुरसुंदरि १२
महामहेश्वरि महाराज्ञि महामहाशक्ते महामहागुप्ते महामहानंदे महामहा श्री
स्फुटे महामहाशये महामहा श्री चक्रनगरसाम्राज्ञि नमस्ते स्वाहा। श्रीं ह्रीं ऐं
एषा विद्या महासिद्धिदायिनी स्मृतिमात्रतः। अग्निवातमहाक्षोभे राजारा

वर्णाद्यंकृदितां इमाः। सुधांनमोन स्वाहांता तर्पणं ताजयां तिथिः। अपचत्रय पं
चधा स्फमा ता स्तुनि त्रिवलास्वपि। ऋषिः छंदो देवता। चैनियोगैः पृथक्
वै ताः। कवर्गमेषु पंपतेरुत्याः मस्या ष्टमातिथिः। अष्टाष्टमातमाहात्म्यवक्त्रं व
र्षशते रपि न शक्यते वरारोहे पंचालिवदनैरपि। सुधांसंकुधिमात्रस्यात् जप
स्तेन सिध्यते। मनसा पूजनं देवं पादुकां पूजयामि वा। स्वाहेति होमरचना तर्प
यामिति तर्पणं। जयदंबं अभायोगस्कातिकक्रांडपंचमी एवपंचाचिधायोगैः
मात्राना त्रितयं लवेत्। अतःपंचदशास्थाना मासा श्री ललितामनोः। सुधा
गाद याः पउधारकतो लवेत्। अत्रलोहकेवतंत्रवक्ष्यते वरवर्णिनी। नमः स्वाहादि
याप पिश्राद्वैसंकुधौसंप्रदानकं। तर्पणेउद्वितीयास्यात् जपेसंकुधिरे वसा। शक्त्या
याः दिपंचत्रितयउपस्थाद्यांक्रियेस्वराः। अवर्णाद्या दशार्णाभ्यांतरकानियोज
नाकृषयः पंचदशधा तेषां धर्मानिभीन्व्यंयितु। उपस्थपायुपत्पाणिवाघ्राणा
निजिह्विकाः दृक्श्रवणाहंतन्मी चित्तानु स्मृषिलयः। प्रधानंकुत्सांकायंडच

नपश्चात्स्मरेत्पार्वति। वरुणश्चैव मित्रश्च धाताचार्यमतास्तथा। अंशश्चैव भगेंद्र
श्च विवस्वान्पूषपर्जन्यमान्। सविता त्वष्टा विष्णुश्च प्रातरर्कोदयः स्मृतः। आसामादि
त्रितया भवेत्। अथ छंदांसि मध्ये गायत्र्युष्णिक् अनुष्टुप् बृहती पंक्तिरेव च। त्रि
ष्टुप् जगती चैव तथा तिजगती मता। शाक्करी अतिपूर्वा स्यात् हष्टिरत्यष्टितः स्मृ
तः। धृतिश्चातिधृतिश्चैव कृतिः पंचदशोरिताः। एतेषु मातृकायास्तु क्रमतः क्रम
श्चरो। क्षेत्रपालिनामंत्रवर्णाद्याः क्रमशो लिखेत्। पालिनां नामनाद्यैः शिरसि लि
लिनां क्रमयां विद्या। सर्वत्र पालिनां तंत्रे देवता चेन्नभाषितौ। सचादिकुलनंदन
लोगमोहादि लेदत्तं आदिमंत्रवर्णास्वि वर्णानां विशेषेण मुदाहृतं। एवमेव मंत्र २४
कामेशां पीठरूपमुदाहृतं। कामेश्वरस्य कामेशी एकवीरस्तथैव च। सा ईश्वरस्य ईश्वरी दे
वी पालिनां कारमारमौ। कुरुध्याश्च चकृत्वा पाद पालिनी इति कामरामारस्वती समर्च
हः क्रमशः कारमर्हनौ। हरनाथः कामशिवो पालिनां हरवल्लभा। लक्ष्मीश्चैव त
तां जिह्वा हिरण्या हृदयेश्वरः। सर्वेश्वरोऽथ सम्पत्जननी पालिनां शिखा। करुण

२५

करु कामेशः कामकोटिश्वरूढः। लीलावती च पालिनां क्रमो पालय एव नायकः। हरि
श्वरी हिरण्या स्वमाकुलनंदचतुर्थकः। विश्वं मिथुनरूपेण देवताः परिशीलिताः। नि
नियोगं प्रवक्ष्यामि साधनास्य एव प्रियो। स्वयं पादुकां सिद्धिरंजनं विप्रलिप्त
रुद्धं वाग्देहलोशक्तिथं ते चाणिमाद्यष्टसिद्धयः। वश्याकर्षणसंमोहस्तंभनानि
च भैरवनः। अथ सर्वेषु मध्यस्थि नित्यानंदस्वरूपकता। एते पंचदश प्रोक्ता मालानां फ
पतां गताः। त्रितारितादि श्यामा वंते तु शांतविनमस्ते आदिरुद्राणि सर्वमि
तत्र लिख्यते। शुद्धराज्ञः रथमाना पितृरुक्ति विह्निति परा। सङ्गाद्यमापादे
पनं प्रयत्नं कुर्मि क्रमः। प्रकृतिश्च धराज्ञा रत्नं त्रिसंध्यं परिशीलयेत्। सर्वमा
लपेत्पुण्यं सम्यग्पुरुषोत्तमे। एकवारं प्रतिदिनं दश पंच स्वयो जपेत्। मरापा
तक निर्मुक्तः सर्वपुण्यमवाप्नुयात्। सङ्गाद्यमापामाद्यसप्ताह दिवसावधि।
अद्य साधसमपि वक्ष्ये आकर्षयति मोहिनी। मासमेकं समाहृत्य स्त्रिजमुत्तमा। स
साध्य साध्य जाप्यारचितैः त्रिविधैर्मुच्यते गदैः। सङ्गाद्यमापि कालापी नित्यं पु

एवमया जपति। जप्तेन गिरिवत्रस्त्रैचीकेनेन्द्रनष्टतनैः। झलहो मस्तर्पणत्वामं
त्रशाक्तिप्रलाचनः। पुष्पाज्यतोयान्नावेपि जपमात्रेण सिध्यति। आप्तानां कु
धिस्त्रो धार्यं मापास्तुनि रिवप्तास्वपि। ग्रथनस्य प्रकारस्त्र दिङ्मात्रेण प्रदर्शिते
ऐं ह्रीं श्रीं ॐ नमः त्रिपुरसुंदरि हृदयदेवि शिरोदेवि शिखादेवि इत्यादि महाश्री
चक्रनगरसम्राज्ञि नमस्ते नमस्ते नमस्ते स्वाहा इत्यंतस्य शुद्धशक्तिमाला मंत्र
स्य। उपस्थेंद्रियाधिष्ठायि वरुणादित्य ऋषयः। गायत्री छंदः। सात्त्विककका
रलकारकपीठस्थित कामेश्वरांकनिलया कामेश्वरी ललिता महालक्ष्मीरिका
देवता खड्गसिद्धये विनियोगः। नादुरं खड्गमाप्नोति येन हस्तस्थितेन वै अष्टा
दश महाद्वीपसम्राट्कल्पो भविष्यति। ऐं ह्रीं श्रीं ॐ नमस्त्रिपुरसुंदर्यै ॐ नमो हृ १०५
दयदेव्यै नमः। शिरोदेव्यै नम इत्यादि नमोमाला मंत्रस्य वाय्वाधिष्ठायि नि मि
त्रादित्य ऋषिः। उष्णिक् छंदः। ऐकारलकारकपीठस्थित ऐश्वरीकामेश्वरांकनिलया
ऐकला नाम ललिता महालक्ष्मीरिका देवता पादुकासिद्धये विनियोगः। ना

शंपादुकायुग्मं प्राप्नोति नवलक्षीमान्। यदाक्रमणमात्रेण करणानु त्रिभुवन
न्नमः ऐं ह्रीं श्रीं ॐ नमः त्रिपुरसुंदर्यै स्वाहा। हृदयदेव्यै स्वाहा। शिरोदेव्यै स्वाहा। इ
त्यादिशक्तिस्वाहा। मालामंत्रस्य पदेंद्रियाधिष्ठायि धात्रादित्य ऋषिः। अनुष्टुप्छं २०
दः। ईकारलकारकपीठः ईश्वरस्य ईश्वरनाम कामेश्वरांकनिलया। ईश्वरीनाम ललि
नामहालक्ष्मीरिका देवता अंजनसिद्धये विनियोगः। सिद्धांजनममाप्यतेनो
जितविलोचनः। निधिं पश्यति सर्वत्र लक्ष्मीस्तेन समृद्धिमान्। ऐं ह्रीं श्रीं ॐ नमः त्रि
पुरसुंदरीं तर्पयामि। हृदयदेवीं तर्पयामि। शिरोदेवीं तर्पयामि। इत्यादिशक्तितर्पण
मालामंत्रस्य पाणींद्रियाधिष्ठायि अर्यमादित्य ऋषिः। बृहती छंदः। सात्त्विकलकार
लकारकपीठस्थित ललिताकरसारकामेश्वरांकनिलया ललिता नाम ललिता लक्ष्मी
रिका देवता वित्तसिद्धये विनियोगः॥ सिद्धवरं महत्प्राप्य पाताललयोगिनः
दृष्ट्वा ततः प्राज्ञसिद्धिः नवलक्षाः स्तुरवीरुनचेत्॥ ऐं ह्रीं श्रीं ॐ नमस्त्रिपुरसुंदरि विजि
यजय हृदयदेवि विजयजय शिरोदेवि जयैत्यादि जयमाला मंत्रस्य वागिंद्रिया
धिष्ठायंशादित्य ऋषयः पंक्तिः छंदः सात्त्विक क्लींकारलकारकपीठस्थितकच्छपन

ऋमिश्वरीमनित्याइतिरवानामलङ्घारि मे देवता बामसिद्धौ विनियोगः॥ वा
ममिधिर्द्धिधम्मोक्ताः शापानुग्रहे ऐं क्लीं ममहाक्षविचरूपावालकस्तेन हृयास्य
हैमितिशाक्तिमाला पंचकं॥ ऐं ह्रीं श्रीं ॐ नमः त्रिपुरसुन्दरि हृदयदेवि शिरोदेवि या
हिमहाश्री चक्रनगरसम्राज्ञि एनमस्ते नमस्ते नमस्ते स्वाहा॥ ईश्यस्य स्वधशिवमा
लामंत्रस्य ब्राणेंद्रियाधिष्ठायि लगाहिय ऋषिः त्रिष्टुप्छंदः। लोगवइत्यारलङ्घा
रपपीठस्थितां इतिनिलाथिना। विलक्षितां मो इति महेश्वरमहालङ्घार मो देवता।
दिहसिद्धौ विनियोगः॥ नयासिद्धानितेलकः शरीरं येन पार्वति। सुचमोसन
नघ्नस्यस्य दाचिन्नुक्तापिनक्य। ऐमित्यादिस्कंदरायानमः। हृदयदेवायनमः॥
शिरोदेवायनमः इत्यादि शिवो नमो मालामंत्रस्य रसनेंद्रियाधिष्ठायि रुद्रादिय १०५
ऋषिः जगती छंदः लोगल्ममारलङ्घार मपीठस्थितः सरस्वती नाम। ततिनाल
षितां मः सर्वज्ञनाम महामिश्वरलङ्घार मो देवता। नोहसिद्धौ विनियोगः॥ वक्ष
इत्वस्य रेनितो हि महविर्धशिवो मंत्रीलाबमाप्नोति येनस्यात् शिवकल्पतः॥
ऐमित्यादिस्कंदरायस्वाहा॥ मालामंत्रस्य चक्षुरिंद्रायाधिष्ठायि विवस्वान्दीय दि
ह्रः शिः इत्यादिशाखा। २१

ज्यस्य विष्णवे। तुरंगनस्कंदलयेसंग्रामिमपितस्त्रवे। समुद्रयानविक्षेपोल्ल
नमेनादिक्षेलये। जगिनी हननात् यक्षरक्षः कूष्मांडजेलये। अपस्मारक्वरया
धिस्वकल्माषादिविषलये। मित्रस्नेहे गुरुलये। यस्मानित्या लियारवे। अन्येष्व
पिच दोषेषु मालामंत्रं स्मरेन्नरः। सर्पे पिङ्गनिर्लेके साक्षात् शिवसमो लवेत्॥
आपनातिनियसुजां विस्तरा च्चतुमरुमः। एकवारं जपेमे देवानो सर्वसृजाम
स्तं ततित्। मालामंत्रविधानं च प्रवक्ष्याम्यतु स्ववशि। सर्वमंत्रस्य संसिरेननु ८६
ज्ञाचानरोलवेत्। नवावरणदेवीनां ललितायामहोजसः॥ एकत्रगणनास्त
पावेदवेदांगगोचरा। सर्वागमरहस्यार्थस्मरणात्पापनाशिनी ललितायां
महेशान्यां माला विद्या महीयसी। नरवश्यं नरेन्द्राणां वश्यं नारीवशंकरी। आणि
मादिगुणैश्वर्यरंजनं पापभंजनं। तत्तदावरणस्थायि देवता मंत्र हृदजं मा
लामंत्रमयं गुरुत्वं चरंधाम महीधनि। शाक्तिमालापंचधास्यात् शिवमाला
चनाहरी। इंद्रमालाचताइत्स्यादिवं पंचदशाक्रमात्। एवं ललिता मंत्र

१०३